DPN 5468

Title : गर्भगीता / GARBHA GĪTĀ

Run. No. 6159 | Cat. No. | Micro. No.

Subject दर्शन / Philosophy | Religion : ✓ Hindu / Bauddha

Language : ✓ Skt. / New. / Nep. / Skt. - New. / Maith. - New. / New. - Nep. /

Size in cms. 26 × 8 | ✓ Folios 9 | Lines (in a page) 7

✓ Compl. / Incompl. | ✓ Chapt. / act / 1–8

Author / translator

✓ Scribe / donor आमरसिंह देवज्ञ ~~दैवज्ञ~~ वर्मणा, Daivajna Amar Singh ~~Daivajna~~ Varmaṇā

Date: NS / SS / VS / KS

Ruler / place

Script : ✓ New. / Dev. / Bhuj. / Ran. /

Illus. :

Material : palmleaf / ✓ paper / thyasaphu /

Condition : fine / ✓ damaged by worms, ✓ rats, ✓ water /

Beginning, colophon, post-colophon :

१ श्रीगोपालाय नमः ॥ अर्जुन उवाच गर्भवास जला (जा) मृत्युं किमर्थं भ्रमते नरा ॥ किमर्थं
रहिते जन्म, कथं कृष्ण जनार्दन ॥ १॥

Colophon/समाप्त —

इति श्री कृष्णार्जुन संवादे गर्भगीता ~~[illegible]~~ नाम अष्टमोध्याय समाप्त :॥ ॥शुभ॥
लेखक देवहा अमर सिंह वर्मा॥ ॥

0
5
10
15
20
25
5

१५६ ~~[illegible]~~ गर्भगीता

श्रीगणेशाय नमः॥ अर्ज्जुन उवाच॥ गर्भवासजरामृत्युं किमर्थं भ्रमते नरा। किमर्थं रहिते जन्म कथयस्व
जनार्द्दन॥ १॥ ॥श्रीभगवानुवाच॥ मानवामूँधमूढस्य संसाराविषयद्भ्यत। आशायत्ने स्यतुप्राणी जीव
नेवसमप्रया॥ २॥ ॥श्रीअर्ज्जुन उवाच॥ आशाकेन जिता प्राणी संसारविषयबन्धना। केनकर्म्मप्रकारेण ला
कादकत तिर्वंधनं॥ ३॥ श्रीभगवानुवाच॥ आशाकर्म्मपरित्यागी संसारी गृहमन्यदि। निष्कर्म्म सर्वकर्म्मेषु पु
नःजन्म न विद्यते॥ ४॥ ॥श्रीअर्ज्जुन उवाच॥ कामक्रोधस्तथा लोभ त्रुमामाया ततथैव च। एवं मनवल
न कर्म्म नास्ति कथं भवि॥ ५॥ ॥श्रीभगवानुवाच॥ ब्रह्मज्ञानदग्धेन कर्म्म पुनःजन्म न लिप्यते॥
निर्मलं च मनं कृत्वा पुनःजन्म न विद्यते॥ ६॥ ॥श्रीभगवानुवाच॥ मनसा पुण्यपापानि गृहस्तुवि

गुचिमर्त्तं ना। शून्यवं मनस्यवर्त्तते कर्म नास्ति कथं हरि ॥ ७ ॥ ॥ श्रीभगवानुवाच ॥ यत्सर्वं कृताक
र्म कर्म विपू समन्वितः। संकल्पाविकल्प द्वयानास्ति पुनर्जन्म न विद्यते ॥ ८ ॥ ॥ अर्जुन उवाच ॥ धन
न्यासूतवंधु न्नाभाराग सूखानि च। शून्यवं मनस्यवर्त्तते कर्म नास्ति कथं हरि ॥ ९ ॥ ॥ श्रीभगवानु
वाच ॥ धनदारा सर्वनाशे रागभावसूखानि च। हृति यागवन्तात्मा पुनर्जन्म न विद्यते ॥ १० ॥ ॥ अर्जुन
उवाच ॥ मनसा मा तं गच्छेयन मनसा तस्य वर्त्तते। अकृतियविहि काले कर्म नास्ति कथं हरि ॥ ११ ॥ ॥ श्रीभग १
वानुवाच ॥ मनसा मा तं गच्छेय ज्ञानेन्द्रियं मर्जुन। गुप्त ज्ञानवन्तात्मा न पुनर्जन्म न विद्यते ॥ १२ ॥ ॥
इति श्रीकृष्णार्जुनसंवादे गर्भगीतायां प्रथमोध्यायः ॥ ॥ अर्जुन उवाच ॥ गृहीत्वा त्यागसंन्यासं पुनर्जन्म नास्ति

यते। तस्य जन्ममृत्यु गर्भेयन्तर्के न पुनः पुनः ॥ १ ॥ ॥ श्रीभगवानुवाच ॥ सर्वकर्म कृतानास्ति संन्यासंत्याग
वानरः। पुनः कर्म हि वर्त्तते निर्माणवर्त्ते तस्य किं गति ॥ २ ॥ ॥ अर्जुन उवाच ॥ त्यागं त्यक्त्वा त्यासं संन्यासं
त्यागश्चायते। वैराग्यं क्रमतस्तीर्थं किं कर्त्तस्य कभाव ॥ ३ ॥ ॥ श्रीभगवानुवाच ॥ त्यागसास्क्रमतस्तीर्थ वैराग्यं
गृहीत्वा यदि। उद्धर्वंति सप्तकलान्तानि यस्य पूजा हि योगिनां ॥ ४ ॥ दुर्लभं त्यागसंन्यासं दुर्लभं वैराग्यसाधनं। दु
र्लभं बुध्यते बीज दुर्लभं सत्य हीनता ॥ ५ ॥ ॥ अर्जुन उवाच ॥ कोयानं धर्मसंभवे तु लक्ष्मी रूपनं कृत।
यद्दित सर्ववस्तूनि वैराग्यं च साधनं ॥ ६ ॥ अर्जुन उवाच ॥ किं वैराग्य चक्षुनासिकि वैराग्यं क्रमतमाहि ॥
किं वैराग्यं कर्म धर्मं पूर्ण भयरमव्ययं ॥ ७ ॥ ॥ श्रीभगवानुवाच ॥ नचित्तं वैराग्यं वैराग्यं ज्ञानं वैराग्यं च

मत्कृते ॥ ८ ॥ हाम्यं हृवति वैराग्यं हाम्यं हृवति यागिन । हाम्यं व विभूतहकाय हाम्यं वज्ञानिनानया ॥ ९ ॥ अर्जुन उवा
च ॥ ज्ञानस्य किम रूपस्तु कथं ज्ञानस्य विक्रय । ज्ञानस्य किम ज्ञानामि कथं ज्ञानामि केशव ॥ १० ॥ ॥ श्रीभगवानुवाच ॥
दुर्वर्णशील वर्णना कि शून्यं अनड ऊर्ध्वं स्थूलतन सूक्ष्मं वर्णेन वर्णं निराकार सर्वज्ञ गुणमर्जुन ॥ ११ ॥ शून्यं तन्मध्ये
तलि वर्णना कि सूर्यवारतनाम्य । तस्कूल निराकार कथं हृवतु ॥ १२ ॥ श्रीभगवानुवाच ॥ यत्र यत्र गमतादृष्टा तत्र २
तत्र हृशून्य यह । तस्य मध्ये महाशून्यं तत्र विलायते मम ॥ १३ ॥ तन्मध्ये विलीयते शून्यं शून्य मध्ये विलीयते
प्रकृति तत्र मन स्थिर हृवतु ॥ १४ ॥ इति श्री कृष्णार्जुन संवादे गरुडगीता द्वितीयो ध्यायः ॥ २ ॥ ॥ अर्जुन उवाच ॥
जयदेक थितितत्त्व देवदेव जगद्गुरु । यत ज्ञानामि सिद्धं तत्त्व कामनि तस्य केशव ॥ १ ॥ श्रीभगवानुवाच ॥ वतादशी

कृतायन तीर्थ हि मन तय तनया । वैराग्य स धर्मं यस्य एव मुक्ति हि यांतिव ॥ २ ॥ हृवि स्मरति तनायास सत्यवादी
सदा शुचि । मिथ्या पवाद न हित तस्य मुक्ति हि यांतिव ॥ ३ ॥ पूजा मे गीत गायनं अर्जुन यादृ ताज्ञामि । होकि एता थ
च मुक्ति हि यांतिव ॥ ४ ॥ यस्य त्रिलद याधर्म सूक्ष्व सत्ता यस र्वदा । तस्य सर्वप्रकाशन तस्य मुक्ति हि यांतिव ॥ ५ ॥ ज ॥
अर्जुन उवाच ॥ कथं देव त्वया वास कथं देव त्वया प्रिय । एतत्सर्वं यथा देव ब्रूहि मय प्रधान सम ॥ ६ ॥ श्रीभगवा
नुवाच ॥ तुलसी रूप नं यस्य मम हि कि सदा नत ॥ शुद्धियानि जिज्ञासा तत्र वसति अर्जुन ॥ ७ ॥ मम प्रिया अ
याची मम वा प्रियर्पि ता । मम प्रिय जयतस्य मम हृका मम प्रिय ॥ ८ ॥ मम प्रियो वक्रूपी मम प्रियक वचवक ।
मम प्रिय धनक धारी मह का सूर्प प्रिया ॥ ९ ॥ मम प्रिय थी थवासी मम प्रिय वन वासिका । मम प्रिय [illegible] तावहो

महकाः सूर्यवत्प्रिय ॥ १० ॥ इति श्रीकृष्णार्जुनसंवादे गर्भगीतानाम द्वितीयोऽध्याय ॥ ॥ अर्जुन उवाच ॥ ॥
भक्तवत्सल भगवान् तत्त्वं भक्ति सदा प्रिय । कथं जानामि त्वया भक्ति इदं ब्रूहि जनार्दन ॥ १ ॥ श्रीभगवानुवा
च ॥ या भक्ति वसंतो सि इन्द्रियाणि ग्रहकृत । मानपवा नहीनास्ति सुखदुःखमनवाञ्छितं ॥ २ ॥ निवासी निस्पृ
हानि र्य कर्म्ममुक्ति नवाञ्छिता । सहजानन्द ज्ञानन्द रूपा हृद विवर्जिता ॥ ३ ॥ न संभक्त नामित्राणि हेताहत
विवर्जिता ॥ कामक्रोधं च वर्जिता स्वभक्ता अर्जुन ॥ ४ ॥ नमस्कारं सुखदुःखा नवाञ्छिता धनया पिता । नवाञ्छि
ता पूजायोग्य नवाञ्छिता मुक्ति अर्जुन ॥ ५ ॥ किं जाति के धर्म्म कार्य्यं किं लोकामित्र बांधवा । किं लोगं किं सुखकाम
किं कर्म तस्य निस्पृहं ॥ ६ ॥ जीवन्ती मुक्ति ये भक्ता केवलं यस्य हृषिता तन कर्म्म नलिप्यंति पद्मपत्र उदके ३

यथा भक्तावयदा चचिन्तं भक्ति सदा प्रिया । तन कर्म्म न लिप्यते ॥ यस्या चिता हृतिं स्मरंतं तस्य किं कथाति
यम ॥ गर्हनपातितयूर्ध समर्थ हतस्याऽर्जुन ॥ ९ ॥ जलस्थ यथा पद्मपत्र जलेन लिप्यते । संसारस्थित
भक्ता पुनः संसारे न लिप्यते ॥ १० ॥ यस्य ज्ञानस्य चरतार्यन संसारकनककामिनी । ज्ञानाज्ञानस्य मुक्ता
हं संसारः सर्वं यं धनं ॥ ११ ॥ अहंकारं हतत्यागी अकर्म्मिकर्म क्रियते । अर्जुन उवाच विद्यया नास्ति कथं मुक्ति
जनार्दन ॥ १२ ॥ ॥ श्रीभगवानुवाच ॥ ब्रह्मकर्म सदालीन सदा ज्ञानमीमंवनं । अहंकार हतं ज्ञानि अन
कतासनं वनं ॥ १३ ॥ सर्वभासंति सूर्याणां सर्वभासंति ब्रह्मज्ञानि । कथं पश्यं चक्षुहीन ॥ १४ ॥ ब्रह्मज्ञानम
नसानं अज्ञानं विषया गुचि ब्रह्मज्ञानमेतत्त्वं किं कथाति सर्व किल्विषं ॥ १५ ॥ कायूहायसहस्राणि क

।।का रुस्म कृतं ॥ तथा दर्हं निपायानि त्रुक्म ज्ञानसमाचयन् ॥ १६ ॥ ॥ अर्जुन उवाच ॥ मनवंचन जिताथ
न ॐ इन्द्रियाकन विग्रहं । कर्मकन कृतं नास्ति कालाकन वसीकृता ॥ १८ ॥ ॥ श्री भगवानुवाच ॥ गुरुध्यान मनः
कृत्वा ॐ इन्द्रियानि ग्रहं कृतं । कर्म अकर्म कर्तं नास्ति निर्गुन काल वसीकृता ॥ १७ ॥ ॥ ॐ इति श्री कृष्णार्जुन सं
वादे गर्भगीता चतुर्थोध्याय ४ ॥ ॥ अर्जुन उवाच ॥ अल्पआयु अर्थहीनस्य पापि दुःख विक्लव ज्ञानव । ब्रह्मा ४
संद निरंजन ब्रह्म [illegible] कथानिव ॥ तनपायपश्नूनु गर्भ कृत गर्भस्य बालक । यवगुनु कृता निंद्रा ब्राह्मण
स्य निंदिता तनया पश्नू पार्थ वर्ण्ण कथा भवन्तन ४ ॥ ॥ अर्जुन उवाच ॥ कृष्ण सूना जलपिबति जानि ॐ इन्द्रियाः
चंचली विषनार्यां सिता वदा । कृतिया सूना न गुरू तनपाय पश्नू पार्थ जन्म भवेजीवक । जनी नासि गृहीनंदीना

गर्द्धच कर्तं पूज्य ४ । तनपाय पश्नू पार्थ जन्म भवति उर्द्धमुखा ॥ पयपूजय वत्ता नारी आपयपूजय पाविकृत
तनपाय भवर्व ज्या सफल जन्म गनिका भवत ॥ कुलवंतिय तदानं ब्रतकथा निर्खं तिर्वं तनपाय पश्नू पार्थम
नगर्भस्य बालकं ॥ गोता बालकृता यत्न गोते नारी पसगिता तनपार्थ पश्नू पार्थ जन्मवा तनयाभवत ॥ द्विजाः
बालपुत्रस्य वदा यास्य न क्रियते इविह किं कृतानां क्रियता भवति का द्विज ॥ १० ॥ सती सत्तदया धर्म्म ज्ञानवानः
कृता गुविपाय पवृद्धिनता यानी प्रभा भवति जनमा ॥ मिथ्यासाषि नर्दतन मिथ्या पापनता गानी । मिथ्या वेवक
र्थवा कं नगेव पित्रनासकं ॥ गृहीतं विनदानानि नदाकव्यसकिं किंड । तनुपाय भवयाघ्र पश्नू पापु सूतर्द
न विस्वासं पयकता हतं निस्वासं पचयीतिव ॥ तेन नानानरकं यान्ति रौरवं च नरकं व्रजत् ॥ कूमानयंति

यत्नी व स्का। नागुरूया। पिता। गमनारी परसंगत्न नर्कयोनिधर्मागति ॥ समर्गच वनंदर्ग्वं दर्ग्वं यनयनित्र
हे। तूनयाप रुव कुष्टि नर्क पतं क्ति तनवा ॥ गुरूवेषी जनयुत तितपस्व नांन्यय वेषी कृतायनतन लिखूति।
अई नगुरू विप्र नृपघाती नाग्निसाध्वी तपस्वनी। ततनवा नर्कगच्छति यावचं॰॰ त्तिवाकरा ॥ आत्मार्थवाङिका
स्वाःर्धप्रश्न नपनघा टक। पनीकथेयत्र ॰॰ काः कथं मुक्ति जनार्दन ॥ ॥श्रीभगवानुवाच॥ आत्मार्थयनघा
तीयना नयनघाटकं। ततयाधयतनानक किंगर्हरुव तिपद ॥ कुलधर्म्मपरित्यागी सुधर्म्मकर्म्मकानयतु॥
ततनासुवर्गनगच्छति पनकायनया पिता ॥ सुधर्म्मवय॥ रुवक सुधर्म्मादि सुनावावी। सुधर्म्माजितेंद्रीयव॥
लं। उत्तमर्य पतिव्रतानारी उत्तमंन्न्यधर्मका ॥ उत्तमानंद्री नंग्रहे स्त्रीयात पय्रतिरुक्ति न्यधर्म्मसत्यवादि ७

कांक्ष त्रियातयनले मूनाजतीतपाङ्गितान्त्रिय ॥ नव विष्णुपर्नंदर्वं नवगंगसमंनदी। नव विप्रसमावर्ण्
नवानी कं भावान्यव ॥ नतुल्यं तीर्थ धर्म्मच नपातागुनूतुल्यंके। ननारी पतिव्रतातुल्यं नतुल्यं यदि निग्रहे
नतुल्यं क्षत्रियाचले गुला नतुल्यं सत्यवादीननां नतुल्यं दया धर्म्म नतुल्यं कादशीव्रत ॥ ॥
॰॰ति श्रीकृष्णार्जुनसंवादे गर्हगीता पंचमाध्याय ५॥ ॥ अर्जुन उवाच॥ सुकर्म्म विसूकर्म्मंच कथं उत्पन्न
केशव ५। कथं कर्म फलं तस्य ॰॰ दंब्रुहि जनार्दन ॥ ॥श्रीभगवानुवाच॥ अयूतं क्रियतं कर्म्म बीजरुवति
क्षि सृन। धवलाकमनूष्यानां नगच्छंति जनार्दन ॥ बध्ककर्मलस्यनं ॰ ला। कर्मलक्षी लहतहवि। तनू
हयकर्मदं विषं प्राकं कर्मना स्विप्रार्थयतु ॥ कर्मच रुवनतसीता। कर्मंणाभिवरवर्तिनं। कर्मेनामवनावा

स कर्मसाक्षिजनार्द्दन॥ कर्मणामवलिप्यंधो कर्मणाजायते सन्निभं। कर्मसंकटवाहनास्ति कमना कि
जनार्द्दन ॥ पूर्वकर्मसमयतयोर्थे पूर्वकर्म पृथागिनी। पूर्वकर्मपूमहाश्रोता कर्मनास्ति ॥ ललाटलिखि
तं कर्मतेनानुवर्तितान्यथा। सुखदुःखं हृदयंनास्ति अप्रलयप्रवर्तिष्ठति ॥ देवलोकमनुष्याणां मुनिगंध
र्वज्ञानिनां। कर्मपूर्वंधर्मसर्वं निकर्मनिवर्त्ततितना ॥ ॥श्रीभगवानुवाच॥ निकर्मनिरंजनदेव सर्वाः ३
त्माचैवपूजितं। निरंजनो सर्वहर्ता प्रकीर्त्तिव कथं रूपि ॥ योनासीनकर्जीवात्मा व्यापीयहरवनेत्रयं। भक्ता
त्माभावीनसर्व लिप्तप्रकृतिदाहिनां ॥ कर्मस्वभावदेहस्य प्रकृत्यसर्वनिर्मिता। समूहकालेनास्ति वपश्य
तजलंयथा ॥ निर्मलो निर्गुणं श्रोता अंबुजदालहरुवन् निर्गुणं सगुणंदेहा सूर्यमकविनस्यति ॥ यथासे

लोविदूस्थन्नी। मनाजानंवअग्यानं मनोधर्मसंबंधकर्मे। मकवीजरूपात्त्वर्धं वदृवीजंबजायत ॥ तथानेमकम
लेपाथर्वदृकर्मजकानयत। मनसाधिष्ठिता मया आगिमनावार्वदिष्टिनारुवत ॥ मनसाज्ञानवेत्ता कथ
कर्मनलिप्यते। स्वयंजीवस्वयंकाल स्वयंमृत्युस्वनिश्वयं ॥ स्वयंपुन्यस्वयंपाप स्वयंकर्मनिलिप्यते ॥ ॥
अर्जुनउवाच॥ कामनस्यादियतदानं कोकस्यप्रतिगृहीता। कावाभोगंवकर्त्तव्यं कावादुःखसायहयत ॥ ॥श्रीभ
गवानुवाच॥ स्वयंदातास्वयंभोक्ता स्वयंभोगकर्ता निर्यमे। रूपनकजदुःखंवस्वयं निर्लेपअर्जुन ॥ अर्जुनउवाच
कथंभूत्यंजन्मत्यंच कथंवावस्थितायपुनः। कथंप्रलयसंहारं ब्रूहिमेवजनार्द्दन ॥ ॥श्रीभगवानुवाच ॥
स्वयंभूत्वंस्वसन्त्यंच स्वयंस्थितयपुनः ॥ स्वयंप्रलयसंहारं स्वयंनिवलमर्जुन ॥ इति श्रीकृष्णार्जुनसं

॥ …दनरुंगीतासा सप्तमोध्याय ४॥ ॥अर्जुन उवाच॥ कथिता देव महाज्ञानं नानार्थं यत्न दुर्लभा। कर्तव्यं
न महाश्चार्थं निर्वानं च कथं इति॥ ॥श्रीभगवानुवाच॥ स्नानं यज्ञ क्रिया जाप्य व्रतपूजा पितृकार्य ४। इति हि कि
विनाशाथ सर्वकर्म विनाशकं॥ नाना देव कृता पूजा नाना कर्म कृतानि य ४। मनः हि किं न जानामि सर्वकर्म विनाः
शक॥ कोटि कोटि क्रिय कृत यज्ञ दानं कोटि गजानि च। यज्ञ कोटि सहस्राणि न मुक्तिं च विनाशनि॥ कोटि जन्मकृत ग
पापं पूनर्स्त्विति स्मनहीं। सर्वपापप्रनाशं च विष्णुलोकं स गच्छति॥ न च न कि नरा मूर्ख नरकं कर्म यान्ति न। अ
मार्गवृद्धिनतामानि पत किं न न क गुरु वो॥ ॥अर्जुन उवाच॥ किं धर्मं किं तपं तीर्थं किं जल्पं च धर्मक्रिया। किं च धर्मं
इस्माविता कहा किं कयमूलं सकारण॥ ॥श्रीभगवानुवाच॥ न माक ध्यान न आसनं न मार्दन यतित्व जपं। न मार्द

वं जल वृक्षिं उदकं उत्थ बोधन। तथापि विविध्व उत्पत्ति भूत कृतान् सूतर्जुन॥ ॥अर्जुन उवाच॥ निर्गु
णात्सगुणं पूर्व पूत्यय प्रयत्न गुणेह वर्त। कर्तव्य सर्वं बन्धनं पार्थ दं देव हि जनार्दन॥ ॥श्रीभगवानुवाच
य न आत्मा निर्गुणं पार्थ जन्मात्मा सगुणं इह वर्त। यत्र आत्मा बन्धनं ज्ञानं जीवात्मा कर्म बन्धनं॥ यत्र आत्मा नि
गुणं स्मृत नास्ति कर्म फल सुखं। नास्ति कर्म इर्ष्य लोकं यत्र आत्मा निर्गुणाइ इस॥ यत्र आत्मा न शीत उष्णं
न दुःख सुखं न सूखानि च। न काल न रूपं न स्थितं यत्र आत्मा निर्गुणाइ इस॥ नाना कर्म कृता लोका नाना कर्मरतं
उपार्जिता। जन्म बन्धन लोका निर्गुणं निर्हर्ष यथा॥ मन ४ सूपार्जितं पूर्व जाय मनु सूपाजिवे। मन ४ सि
नरु वर्बीजं हवनूबीजं लव नित्य॥ स्थितं न तस्य मनं कृत्वा ब्रह्मज्ञानं तत्पर नरा। गेह लोभ च न कर्तव्यं निलायास

मनरीति ॥ इति श्रीकृष्णार्जुनसंवादगर्भगीतायां प्रथमोध्यायः ॥ ॥अर्जुन उवाच॥ मनः सर्वत्र विभुः
मना हि सर्वबली त्वया । मनः सर्वकृताकर्म निर्मलं मन कथं हरि ॥ ॥श्रीभगवानुवाच॥ इदं मनः सर्वव्यापी इ
दं मना हि सर्वबली । इदं मनमनः कृत्वा मनाकर्म न लिप्यते ॥ ॥अर्जुन उवाच॥ द्वितीयं च कथं कर्म संशयं मम
देहं प्रसादं कुरु केशव ॥ ॥श्रीभगवानुवाच॥ मनादीय मनाककुं मना उत्पत्ति प्रलयं गता । मनः अनुकूल मना ८
वीय मनाकर्म न लिप्यते ॥ मना आदि मना देव मना देव निरञ्जनः । मना ह्यब्रह्म न लोकं किं शिवाय वा मना शिव । ॥
मना कालं मना सृष्टि मना पूज्य मना पाप । मनाकर्म फलाशा च ॥ मना हर्म मना दुःखं मना गुण पूर्ण वदनं । मनाः
माच्या मना मोह मना मोहं तम तमः ॥ मना कामं मना क्रोध मना आपं मना पर । मना योगी मना भोगी मनाकः

ख२

र्दशाहारे नमाद्दी स्नान ॐ क्रिया । नमाद्दीय इक्षः सर्व नमाद्दी आपत शुचि ॥ नमाद्दी कर्म धर्म च नमाद्दी स्नान
निग्रह ॥ अत्यन्तं कथं संद्धे पापं हन्यते मनः । किं कृत्वा का छि विस्कृतं ॥ ॥अर्जुन उवाच॥ अत्यन्तं कथं
शुद्ध कथं मनसे वना भानं । मनमेव सदा कस्त कथं च निर्मल मनः ॥ ॥श्रीभगवानुवाच॥ ध्यानात्मा यत्र
क्षेत्र स्नानं च निर्मलं मनः ॥ निर्मलं मन गुरु ध्यानं पापं न च धर्ममन ॥ ॥श्री अर्जुन उवाच॥ कर्माकर्म वि
धाविया लोकानां द्वैरं वंधनं केन कर्म प्रकाशनं लोका कुतानिर्बंधनं ॥ ॥श्रीभगवानुवाच॥ योगिनां किं क
र्मपूजानां च नास्य हृतोकं ब्रह्मज्ञानहर्जं योगिन अवार्यहरिवं नियोगिनां । मान अपमानं आवाहन क्रियते भावि
पत्र माथे तत्त्व निवाश्न अवियहरिवं योगिनां ॥ योगिनां सहजानन्द जन्ममृत्यु न वाञ्छिता । विधि निषेध च हित

...र्यरुवत्या गिनां ॥ यागिनां वमारुरुवसम ४ ७ ॥ ऊ समं वभितया । समताः सर्वहृतषु अवीर्यरुवतियागि
नां । नकर्मो नरु लीयूरुा न क्रियास्त्वकमानी । तत्त्वज्ञो नयतः श्रानीनिराकारीतियागिनां ॥ यागिनां सीतउष्णे उ
...४ स्तनिसर्वानित्य । विषयासर्वजी वमर्का अविर्जरुवतियागिनां ॥ यर्त्वब्रह्म पदं तत्त्वयोगी मूर्खकदावन ४ ।
...त्त्वमहायदवं यागितत्त्वनिरंजन ॥ तत्त्वसाधनिराकारं तत्त्वयागिनिवाश्रय । तत्त्वात्माब्रह्मक्षानंद तत्त्व
नानं यतित्रिका ॥ तत्त्वयूपपितारुक ४ तत्त्वयागि उनाश्रिया । तत्त्वसिद्ध गुरुरूपका तत्त्वदेवनिरंजनं ॥ ॥ २
ॐ इति श्री कृष्णार्जुनसंवाद गरुड़ गीता नाम अष्टमाध्याय समाप्त ४ ॥ ॥ शुभ ॥ लेखक देवब्रह्म शमन सिंह वर्म्म ॥ ॥